University of Mysore

Oriental Library Publications

SANSKRIT SERIES No. 65

अर्थशास्त्रपदसूची

प्रथमो भागः

अकारादिणान्तः

INDEX VERBORUM

TO THE PUBLISHED TEXTS
OF THE KAUTILIYA ARTHASASTRA

PART I

A to Ṇ

BY

DR. R. SHAMA SASTRY, B.A., PH.D., M.R.A.S.,
Curator, Government Oriental Library, Mysore; Director of Archæological Researches in Mysore, Periodical Lecturer to the Post-Graduates' Classes of the Calcutta University, and B.B.R.A.S. Campbell Memorial Medalist

MYSORE
PRINTED AT THE GOVERNMENT BRANCH PRESS
1924

Price Rs. 2-8-0

ಮೈಸೂರು ದೇಶದ ವಿದ್ಯಾ ಇಲಾಖೆ
ಸಂ.
ತಾ.
ಕೇಂದ್ರ ವಾಚನಾಲಯ, ಬೆಂಗಳೂರು

University of Mysore

Oriental Library Publications

SANSKRIT SERIES No. 65.

अर्थशास्त्रपदसूची

प्रथमो भागः

अकारादिर्णान्तः

INDEX VERBORUM

TO THE PUBLISHED TEXTS
OF THE KAUTILIYA ARTHASASTRA

PART I

A to Ṇ

BY

DR. R. SHAMA SASTRY, B.A., PH.D., M.R.A.S.,
Curator, Government Oriental Library, Mysore; Director of Archæological Researches in Mysore, Periodical Lecturer to the Post-Graduates' Classes of the Calcutta University, and B.B.R.A.S. Campbell Memorial Medalist

MYSORE
PRINTED AT THE GOVERNMENT BRANCH PRESS
1924

उपोद्घातः.

कौटिलीयस्यार्थशास्त्रस्येयं पदसूची द्वितीयमुद्रणप्रारम्भात्प्रागेव विरचिताऽऽसीत्. यदा सूचीमुद्रणप्रयत्नात्प्राक् मद्रास् पत्तनस्थप्राच्यकोशागारगतार्थशास्त्रमातृकाद्वयमुपजीव्य लिखितेन मातृकान्तरेणहस्था मातृका द्वितीयमुद्रणार्थं परीक्षिता सम्परिष्कृता चासीत् तदा न केवलं भूयान्पाठभेदोऽपि चेतस्ततोऽल्पशः विशेषश्चतुर्थाधिकरणे पत्रद्वयपरिमितोऽधिकः पाठस्तस्मिन्मातृकान्तरे पर्यदृश्यत. अतोऽधिकपाठसङ्ग्रहेण द्वितीयवारं मुद्रितेऽर्थशास्त्रे पत्रसङ्ख्या प्रथममुद्रितात्पुटद्वयेनाधिका समजायत. बहुशस्तत्र तत्र पत्रेषु पङ्क्तिसङ्ख्या चाभिद्यत. तदित्थं प्रथमं मुद्रितस्यार्थशास्त्रस्य पदानां सूची न द्वितीयवारं मुद्रितस्य पदानि सङ्ग्रहीतुं, नापि द्वितीयवारं मुद्रितस्य पदानां सूची प्रथममुद्रितस्य पदानि सङ्ग्रहीतुमलमिति द्वयोरप्येकत्र सङ्ग्रहो विदुषां पदार्थनिर्णयसौकर्याय प्रभवतीति मुद्रणद्वयमप्यत्र समग्राहि. तृतीयमुद्रणमप्यचिरादेव प्रकाश्यमानं द्वितीयमुद्रणान्न भिद्यत इति तदप्यनयैव सूच्या गतार्थं सञ्जायते.

सम्पूर्णायाः पदसूच्या मुद्रणं दीर्घकालमपेक्षते इति, सा च सूची एकस्मिन्पुस्तके सङ्कलिता दुर्भरं पुस्तकस्थौल्यमापादयतीति अकारादिणान्तैका तादिहान्ताऽन्या इति द्विधा विभक्ता. अत्राकारादिणान्तः प्रथमो भागः प्रकाशित इति विद्वांसो विदांकुर्वन्तु.

कौटिलीयार्थशास्त्रस्य अकारादि पदानुक्रमणिका.

अ

	First Edition		Second Edition	
	Page	Line	Page	Line
अक्रान्तिः	75	2, 3	75	2, 3
अकामं	183	4	183	4
अकामः	153	18	153	18
	173	13	173	12
	189	12	189	13
अकामस्य	155	13	155	12
अकामां	124	15	124	15
	153	18	153	18
	182	11	182	11
	231	5, 10	233	5, 10
अकामायां	229	3, 12	231	3, 12
	230	1	232	1
अकामायाः	124	13	124	13
	230	3	232	3
अकारणक्रुद्धान्	19	15	19	14
अकारणध्वस्तं	290	9	292	9
अकारणागतं	290	9	292	9
अकारणात्	161	1	161	1
	183	8	183	8
	184	17	184	17
	229	18	231	18
	279	7, 10, 13	281	7, 10, 13
अकारयतः	185	3, 5	185	3, 5
अकारादयः	71	20	71	18
अकार्याणां	274	9	276	9
अकाले	66	19	66	20
	126	20	126	20
	139	3	139	3
अकुर्वतः	173	4	173	4

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
अग्नि	227	7	229	7
	228	3	230	3
	271	16	273	16
	307	4	309	4
	312	2	314	2
	354	20	356	20
	355	16	357	16
	388	6, 18	390	6, 18
	391	7	393	7
	392	3	394	3
	393	1, 2, 9	395	1, 2, 9
	396	14	398	14
	414	12	416	12
अग्निं	249	13	251	13
	267	7	269	7
	329	3, 6	331	3, 6
	360	19	362	19
	388	6	390	6
	394	18, 19	396	18, 19
	403	5, 15	405	5, 15
	411	19, 20	413	19, 20
	412	1, 2	414	1, 2
	419	13	421	13
	420	10	422	10
अग्निः	40	10, 11	40	10, 11
	52	4	52	6
	93	4	93	4
	205	15	207	7
	411	18	413	18

	First Edition		Second Edition	
	Page	Line	Page	Line
	29	15	29	15
अङ्गाभिरदने	 227	14	229	14
अङ्गार	 56	11	56	11
	81	15	81	15
	100	17	100	17
	210	5	212	5
अङ्गारराशौ	 419	20	421	20
अङ्गाराणां	 105	5	105	5
अङ्गारान्	... 97	7	97	7
अङ्गारेषु	 414	16	416	16
अङ्गुलं	 106	7, 8	106	7, 8
	132	19	132	19
अङ्गुलः	 106	16	106	16
अङ्गुल्याः	 106	7	106	8
	219	15	221	15
अङ्गुष्ठच्छेदः	... 130	18	130	18
अङ्गुष्ठसन्दंशनं	 115	1	115	1
अङ्गेन	 195	8	195	9
	375	4	377	4
अङ्गेषु	 371	1	373	1
अचक्रखुरा	 368	3	370	3
अचक्षुर्विषये	 370	5	372	5
अचरितव्रतेभ्यः	 165	2	165	2
अचलः	 374	17	376	17
अचापल्यं	 15	12	15	12
अचारु	 75	3	75	3
अचिन्त्यं	 258	6	260	6
अचेतनिकं	 146	44	146	14
अचोरं	 218	15	220	15

	First Edition		Second Edition	
	Page	Line	Page	Line
अचोरं	218	9, 16, 18	220	16, 18
अचोराख्यान	202	18	204	4
अच्छं	86	8	86	8
अच्छः	77	3	77	3
	83	11	83	13
अच्छन्नं	181	8	181	8
अच्छलदर्शिनः	200	5	200	5
अच्छायः	37	11	37	11
	108	6	108	7
अज	60	11	60	11
	97	3	97	3
	422	5	424	5
अजक्षीरैः	82	19	83	1
अजगर	413	5	415	5
अजगराः	418	2	420	2
अजनः	402	4	404	4
अजनां	296	12	298	12
अजपा	349	3	351	3
अजबिन्दुः	11	14	11	16
अजस्र	98	8	98	8
अजाः	162	7	162	7
अजाजि	95	2	95	2
अजातस्नेहे	32	14	32	15
अजात्यं	203	16	205	8
	312	18	314	18
अजात्यः	312	14	314	14
अजादीनां	131	8	131	8
अजानन्तः	213	9	215	9
अजापयः	83	1	83	3

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
अटवीबलप्रायः	 342	6	344	6
अटवीबलात्	 343	3	345	3
अटवीबलानां	 140	5	140	5
	286	7	288	7
	340	18	342	18
अटवीबलैः	 364	13	366	13
	364	19	367	1
अटवीभयात्	 129	1	129	1
अटवीभिः	 291	19	293	19
	355	14	357	14
	381	1	383	1
अटवीभृतम्	 190	9	190	9
अटवीभृतः	 333	3	335	3
अटवीभेदः	 377	17	379	17
अटवीषु	... 280	12	282	12
	339	5	341	5
अटवीसञ्चारं	 141	10	141	10
अटवीसम्बन्धः	 36	1	36	3
अटवीस्तम्भः	 333	1	335	1
अटवीस्थः	 407	18	409	18
अटवीस्थानं	 51	6	51	6
अटवीहृतां	 231	3	233	3
अटव्यन्तपाल	 30	8	30	8
	99	4	99	4
अटव्यपसारि	 289	13	291	13
अटव्याः	 49	17	49	17
अटव्यादिकं	 406	15	408	15
अटव्यासन्नं	 401	6	403	6
अट्टालकं	 52	9, 6	52	11, 8

	First Edition		Second Edition	
	Page	Line	Page	Line
अतिक्रमे	155	2	155	2
	166	8, 12, 15	166	8, 12, 15
	167	4	167	4
	169	20	169	20
	185	13	185	13
	187	18	187	19
	202	13	203	17
	219	9	221	8
	312	5	314	5
अतिक्रम्य ...	14	7	14	9
अतिक्रान्तं	39	5	39	5
	88	13	88	13
अतिक्रान्तः	372	18, 19,	375	18, 19
	374	2	376	2
अतिक्रान्तानां	110	20	110	20
अतिक्रान्तावेक्षणं ...	425	4	427	4
	428	10	430	10
अतिक्रान्ते	342	15	344	15
अतिक्रामति	313	8	315	8
अतिक्रामतः	130	19	130	19
अतिक्रामयेत्	28	20	29	20
अतिक्रामयेयुः	211	6	213	6
अतिक्रामेत्	312	4	314	4
अतिक्षिप्तं	333	14	335	14
	334	16	336	16
अतिगच्छति	418	10	420	10
अतिगतायाः	157	9	157	9
अतिचारदण्डः	3	5	3	5
	235	3	237	3
अतिचारयेत्	389	13	391	13

	First Edition		Second Edition	
	Page	Line	Page	Line
अदासं	 183	10	183	10
अदासा:	 183	12	183	12
अदासीं	 146	12	146	12
	230	10	232	10
अदितिकौशिकवत्	 33	10	33	10
अदिते	 412	7	414	7
अदीन	 256	1	258	3
अदीर्घसूत्र:	 255	14	257	14
अदुर्गमार्गे	 297	16	299	16
अदुर्गापसार:	 309	3	311	3
अदुष्टं	 382	6	384	6
अदुष्टस्य	 17	15	17	15
अदूष्यं	 252	16	254	16
	280	14	282	14
अदूष्यक:	 352	11	354	11
अदूष्याणां	 352	11	354	11
अदृश्यमान:	... 316	21	318	21
अदृश्यमाने	 308	13	310	13
अदृश्यै:	 32	6	32	6
अदृष्टं	 14	11	14	13
	90	8	90	8
अदृष्ट:	 265	9	267	9
अदृष्टकारितं	 258	3	260	3
अदृष्टद्रव्यं	 319	20	221	20
अदृष्टपुरुष:	 268	13	270	13
अदृष्टवध:	 32	15	32	16
अदृष्टसंसर्ग	 392	18	394	18
अदृष्टस्य	 426	10	428	10
अदेयं	 66	19	66	20

	First Edition		Second Edition	
	Page	Line	Page	Line
	222	16	224	16
अदेयानां	 274	10	276	10
अदेवमातृकः	 256	8	258	8
अदेशकालविक्रेतारं	 144	7	144	7
	212	19	214	19
अदेशिकं	 335	11	337	11
अदोषः	 152	6	152	6
	157	16	157	16
	158	12	158	12
	187	5	187	6
	203	5, 7	204	12, 14
	203	9	205	1
	229	9	231	9
अदोषायां	 155	3	155	3
अद्भिः	 164	13	164	13
अद्भुतं	 394	10	396	11
	397	1	399	1
अद्भुतोत्पातैः	 416	6	418	6
अद्भुतोत्पादनं	416	8	418	8
अद्रव्यं	10	5	10	5
अद्वारासङ्गं	 38	17	38	18
अद्वारेण	 214	10	216	10
अद्वितीयं	 152	2	152	2
अद्वैध्यं	 289	7, 17,	291	7, 17
अद्वैध्यः	 256	18	258	18
अधः	 194	16	194	16
अधमः	 338	9, 14	340	9, 14
अधमाः	 362	20	365	1
अधरतटाकं	 169	17	169	17

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
अधिकरणं	425	5	427	5
	429	13	431	13
अधिकरणस्थः	24	18	24	16
अधिकरणस्थाः	383	18	385	18
अधिकरणानां	62	12	62	12
	63	1	63	1
अधिकरणानि	6	1	5	16
अधिकरणी	93	4	93	4
	210	6	212	5
अधिकरणे	7	7	7	5
	9	16	9	16
	11	3	11	5
	49	4	49	4
	50	18	50	18
	54	9	50	9
	69	3	69	3
	147	5	147	5
	151	5	151	5
	154	3	154	3
	202	20	204	6
	231	12	233	12
	244	19	246	19
	240	3	242	3
	247	19	249	19
	255	5	257	5
	257	11	159	13
	260	18	262	16
	264	17	266	17
	266	12	268	12
	281	5	283	5

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
अध्यक्षप्रचारे	 101	3	101	3
	102	18	102	18
	105	22	105	22
	109	16	109	16
	112	8	112	7
	113	13	113	14
	115	8	115	8
	118	16	118	18
	121	19	121	20
	123	5	123	5
	125	19	125	19
	128	8	128	8
	131	20	131	20
	135	12	135	12
	137	12	137	12
	139	9	139	9
	140	14	140	14
	141	14	141	14
	143	13	143	13
	147	5	147	5
अध्यक्षस्थानं	 41	6	41	8
अध्यक्षस्य	 110	17	110	17
	111	18	111	18
अध्यक्षाः	 55	10	55	10
	68	2	68	2
	69	16	69	16
	198	5	198	5
	245	19, 15	247	19, 15

	First Edition		Second Edition	
	Page	Line	Page	Line
अध्याय:	19	20	19	19
	22	10	22	10
	24	8	24	6
	26	6	26	6
	29	19	29	19
	32	7	32	8
	35	10	35	10
	37	4	37	4
	39	18	39	18
	42	8	42	9
	45	9	45	9
	49	5	49	5
	50	19	50	19
	54	10	54	10
	57	6	57	6
	62	8	62	7
	65	11	65	11
	67	22	67	20
	70	16	70	16
	75	10	75	10
	81	11	81	11
	85	8	85	8
	89	11	89	11
	93	12	93	12
	97	17	97	16
	99	12	99	12
	101	3	101	3
	102	18	102	18
	105	22	105	22

	First Edition		Second Edition	
	Page	Line	Page	Line
अध्याय:	109	16	109	16
	112	8	112	7
	113	14	113	14
	115	8	115	8
	118	16	118	18
	121	19	121	20
	123	5	123	5
	125	19	125	19
	128	8	128	8
	131	20	131	20
	135	12	135	12
	137	12	137	12
	139	9	139	9
	140	15	140	15
	141	14	141	14
	143	14	143	14
	147	6	147	6
	151	5	151	6
	154	4, 5	154	4, 5
	157	4	157	4
	159	19	159	19
	162	3	162	3
	163	20	163	20
	165	19, 20	165	20, 21
	167	17	167	18
	170	13, 14	170	13, 14
	173	18, 19	173	16, 18
	177	10	177	10
	181	10	181	10

	First Edition		Second Edition	
	Page	Line	Page	Line
अध्याय:	184	13, 14	184	13, 14
	187	8	187	8
	188	16	188	18
	191	16	191	16
	193	5	193	5
	194	12	194	12
	197	13	197	13
	200	7, 8	200	7, 8
	202	21	204	5
	205	12	207	4
	208	10	210	10
	210	13	212	13
	212	9	214	9
	215	9	217	9
	217	20	219	20
	220	11	222	11
	224	6	226	6
	226	10	228	10
	228	14	230	14
	231	12	233	12
	235	3	237	3
	240	3	242	3
	244	19	246	19
	247	19	249	19
	249	15	251	15
	251	18	253	18
	255	6	257	6
	257	11	259	14
	260	19	262	17

	First Edition		Second Edition	
	Page	Line	Page	Line
अध्यायः	264	18	266	18
	269	12	268	12
	269	19	271	19
	272	13	274	13
	276	16	278	16
	281	6	283	6
	284	6	286	6
	286	18	288	18
	290	18	292	18
	293	12	295	12
	206	15	298	15
	299	8	301	8
	303	5	305	5
	305	19	307	19
	308	18	310	19
	311	10	313	10
	315	10	317	10
	319	6	321	6
	323	4	325	4
	325	4	327	4
	328	20, 21	330	20, 21
	333	7	335	7
	336	17, 18	338	17, 18
	340	14, 15	342	14, 15
	343	20, 21	345	20, 21
	347	5, 6	349	7, 8
	349	15	351	16
	351	19	353	20
	355	19	357	19

	First Edition		Second Edition	
	Page	Line	Page	Line
अध्यायः	361	5	363	5
	362	8	364	8
	364	6	366	6
	367	15	369	15
	369	19	371	19
	373	7	375	7
	375	18	377	18
	379	17	381	17
	381	20	383	20
	384	14	386	14
	386	16	388	17
	389	3	391	4
	392	9	393	9
	394	11	396	12
	398	8	400	7
	401	17	403	17
	406	12	408	12
	408	6	410	6
	412	10	414	9
	416	9	418	9
	423	6	425	6
	424	11	426	12
	429	11, 12	431	11, 12
अध्यासनेषु	195	6	195	7
अध्यासति	38	11	38	12
अध्युष्यन्ते	321	9	323	9
अध्रुवं	289	15	291	15
अध्रुवाणां	177	7	177	7
अध्रुवे	272	9	274	9

	First Edition		Second Edition	
	Page	Line	Page	Line
अनभिधावतः	 145	9	145	9
	199	2	199	2
अनभिमन्येत	 310	19	312	19
अनभियुक्तः	... 273	7	275	7
अनभियोगः	 98	14	98	14
अनभिसन्धाने	 218	15	220	15
अनभिसरतः	 168	10	168	10
अनभिसरतां	 200	1	200	1
	206	6	207	16
अनभिसर्तुः	 207	19	209	12
अनभिसारं	 190	4	190	4
	335	4	337	4
अनमङ्गार्क्ति	 167	3	167	3
अनय	 319	14	321	14
अनयख्यापनं	 392	18	394	18
अनयौ	 7	1	6	16
	258	2	260	2
अनर्घेण	 119	13	119	13
	204	6	205	15
अनर्थ	 4	14	4	13
	63	12	63	13
	327	19	329	19
	356	17, 18,	358	17, 18
अनर्थे	 34	4	34	4
	250	16	252	16
	282	7	284	7
	352	5	354	5
	358	9	360	9
	382	13	384	13

	First Edition		Second Edition	
	Page	Line	Page	Line
अनुगच्छेयुः	171	19	171	19
अनुगताः	228	11	230	11
अनुगन्तुं	382	3	384	3
अनुगुणाः	311	9	313	9
अनुगुणान्	376	4	378	4
अनुगृहं	166	3	166	3
अनुगृहीतः	286	1	288	1
अनुगृहीतलोमभारान्	212	4	214	4
अनुगृहीतव्ये	286	11	288	11
अनुगृहीताः	316	4	318	4
अनुगृहीतुं	346	2	348	4
अनुगृह्णतः	285	19	287	19
अनुगृह्णतोः	285	10, 19	287	10, 19
अनुगृह्णन्ति	273	12	275	12
	274	3	276	3
अनुगृह्णाति	285	16, 19	287	16, 19
	290	4	292	4
अनुगृह्णीयात	47	4, 9	47	5, 9
	114	3	114	3
	126	11	126	11
	208	7	210	7
	282	6, 17, 20	284	6, 17, 20
	283	5	285	5
	286	10	288	10
	310	16	312	16
	315	16, 17	317	16, 17
	316	2, 3	318	2; 3
	317	18	319	18
	318	12	320	12

	First Edition		Second Edition	
	Page	Line	Page	Line
अनल्बणं	 78	11	78	11
अनुवंशं	 372	13	374	13
अनुवर्तकः	 379	16	381	16
अनुवर्तके	 239	18	241	18
	290	7	292	7
	312	18	314	18
	313	1, 4	315	1, 4
	324	17	326	17
अनुवर्तन	 64	20	64	19
	344	20	347	1
अनुवर्तन्ते	 311	3	313	3
अनुवर्तयति	 324	8	326	8
अनुवर्तयेत्	 121	18	121	19
	252	8	254	8
	310	12	312	12
अनुवर्तिनः	 249	7	251	7
	311	9	313	9
अनुवर्तेत	... 13	15	13	15
	15	20	16	2
	35	12	35	12
	250	5	252	4
	406	18	408	18
	407	3	409	3
अनुवर्धेत	 174	14	174	14
अनुवसितं	 190	19	190	19
अनुवाते	 409	9	411	9
अनुवासनं	 133	7	133	7
अनुवासितः	 411	17	413	17
अनुविधायि	 79	3	79	3

	First Edition		Second Edition	
	Page	Line	Page	Line
अन्तर्धानमात्रेण	211	5	213	5
अन्तर्धानयोगाः	417	17	419	17
अन्तार्धिः	265	16	267	16
	301	10	303	10
अन्तार्धितां	290	1	292	1
अन्तार्धिप्रतिवेशः	317	14	319	14
अन्तर्नखः	121	9	121	10
अन्तर्बलं	386	6	388	7
अन्तर्यामं	222	6	224	6
अन्तर्वंशिक	20	13	20	13
	245	8	247	8
अन्तर्वंशिकमुखः ...	252	7	254	7
अन्तर्वंशिकसैन्यं	41	7	41	9
	42	17	42	18
	361	15	363	15
अन्तर्वंशिकहस्तात्	44	4	44	4
अन्तर्वेद्यां	151	13	151	13
अन्तार्हितं	161	13	161	13
अन्तार्हितः ..	24	14	24	12
	386	4	388	4
अन्तश्छिद्रायां	242	14	244	14
अन्तश्शल्यं	333	13	335	13
	334	12	336	12
अन्तश्शल्ययोः	334	11	336	11
अन्ताश्शिखं	105	4	105	4
अन्तस्सारबलं	390	16	392	16
अन्तस्स्थायिनः	352	19	354	19
अन्तस्स्थायिनि	352	17	354	17
अन्तस्स्थायी	352	17	354	17

	First Edition Page	Line	Second Edition Page	Line
अन्यत्र	160	3	160	3
	165	14	165	15
	166	7	166	7
	167	5, 10	167	5, 11
	174	16	174	16
	175	10	175	10
	175	17	176	1
	183	14	183	14
	185	4	185	4
	187	10	187	11
	190	12, 17	190	12, 17
	191	11	191	11
	195	15, 18	195	16, 19
	197	16	197	16
	198	12	198	12
	201	11	201	11
	206	7	207	16
	207	10	209	3
	218	7	220	7
	232	5	234	5
	233	9	235	9
	240	15	242	15
	243	13	245	13
	247	9	249	9
	265	10	267	10
	268	12	270	12
	332	7	334	7
	342	3	344	3
	378	3	380	3

	First Edition		Second Edition	
	Page	Line	Page	Line
अपचरणे	 202	13	202	13
अपचरन्तं	 14	5	14	7
अपचरन्तीं	 230	14	232	14
अपचरित	 273	14	275	14
	426	15	428	15
अपचारिताः	 273	16	275	16
अपचारं	 407	4	409	4
अपचारयेयुः	 376	10	378	10
	387	15	389	15
अपचारात	 203	4	204	11
अपचारिताः	 267	10, 12	269	10, 12
	270	15	272	15
अपचितः	 260	1	262	1
अपजापोपसर्पः	 235	13	237	13
अपजिह्विकायोगः	 410	18, 19	412	18, 19
अपतितं	 199	10	199	9
अपत्यं	 161	18	161	18
	164	3	164	3
	254	14	256	14
	312	8, 11	314	8, 11
अपत्यदारं	 48	3	48	3
अपत्यपूजनं	 393	17	395	17
अपत्यवर्ती	 231	5, 10	233	5, 10
अपत्यसमाधौ	 312	11	314	11
अपत्योत्पात्तिः	 328	5	330	5
अपादिशेत्	... 192	19	192	19
	194	8	194	8
	265	17	267	17
अपदिशेयुः	 314	20	316	20

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
अपहरतः	202	10, 11	202	10, 11
	203	14	205	6
	220	16	222	16
	221	2, 14	223	2, 14
	222	7	224	8
	225	7, 13	227	7, 13
	226	2	228	2
	230	6	232	6
अपहरन्तं	83	15	83	20
	127	8	127	8
	219	20	221	20
अपहरान्ति	332	12	334	12
अपहरेत्	36	8	36	8
अपहरेयुः	313	16	315	16
	397	10	399	10
अपहर्ता	210	10	212	10
अपहर्तारं	211	19	213	19
	378	9	380	9
अपहर्तारः	332	14	334	14
अपहारं			202	13
अपहारः	65	19	65	19
	66	13	66	13
अपहाराः	178	7	178	7
अपहारे	125	4	125	4
	155	11	155	10
	225	1, 3, 4	227	1, 3, 4
अपहारेषु	69	2	69	2
	59	5	59	5
अपहीनं	47	4	47	4

	First Edition		Second Edition	
	Page	Line	Page	Line
अपाहृत	 45	4	45	4
	130	1	130	1
अपास्तपुरुषदोषं	 239	18	241	18
अपास्तस्तेन	 44	19	44	18
अपितृकाः	 160	14	160	14
आपितृके	 154	17	154	17
अपितृद्रव्याः	 160	9	160	8
आपिबन्तः	 340	6	342	6
अपीडनीयः	 220	3	222	3
अपुत्रं	 236	13	238	13
अपुत्रकं	... 61	12	61	12
अपुत्रस्य	 160	10	160	10
अपुत्रा	 153	4	153	4
अपुत्रां	 153	10	153	10
अपुत्रायाः	 153	7	153	7
अपुरुषं	... 233	15	235	15
अपुरुषः	 422	10	424	10
अपुरुषा	 295	4	297	4
अपुरोगस्य	 359	9	361	9
अपुस्तमीविकानां	 64	7	64	6
अपूर्वं	 144	18	144	18
अपूर्वग्रहणं	 10	17	10	17
अपूर्वदेशाधिगमे	 147	3	147	3
अपूर्वस्य	 278	18	280	18
अपृच्छयं	 222	14	224	14
अपेक्षः	.. 266	16	268	16
अपेक्षणं	 269	14	271	14
अपेक्षा	 349	6	351	7
अपेक्षेत	 285	9	287	9

	First Edition		Second Edition	
	Page	Line	Page	Line
अपेयं	231	15	233	15
अपेहि	232	17	234	18
अपोह	10	5	10	5
	255	16	257	16
अपोह्य	211	4	213	4
अप्रजाता	129	5	129	5
अप्रजाता	47	20	47	20
अप्रजाताः	158	17	158	17
	159	1	159	1
अप्रजायमानां	153	10	153	10
अप्रणीतः	9	12	9	12
अप्रणेता	295	12	297	12
अप्रतापः	125	6	125	6
अप्रतिकारः	357	14	359	14
अप्रतिकारेण	274	18	276	18
अप्रतिकार्य	268	2	270	2
अप्रतिकार्यं	268	1	280	1
	271	15	273	15
	329	4	331	4
अप्रतिगृह्णतः	174	15	174	15
	188	1	188	1
अप्रतिगृह्णतां	394	5	396	5
अप्रतिग्रहः	373	4	375	4
अप्रतिग्राहक	97	12	97	12
अप्रतिग्राह्यं	174	16	174	16
अप्रतिच्छन्नं	232	13	234	13
अप्रतिपन्नस्य	345	16	347	18
अप्रतिपाद्यमानं	355	8	357	8
अप्रतिबध्नतः	64	8	64	7
	65	1	65	1

	First Edition		Second Edition	
	Page	Line	Page	Line
अभावे	153	7	153	7
	159	14	159	14
	160	13	160	13
	163	15	163	15
	183	9	183	9
	184	4	184	4
	265	8	267	8
	306	6, 9, 14	308	6, 9, 14
	315	2	317	2
	320	6	322	6
	406	3, 5	408	3, 5
अभिकाशा	368	3	370	3
अभिक्रान्त	374	3	376	3
अभिक्रुद्धान्	19	14	19	14
अभिख्यात:	24	17	24	15
अभिगच्छन्	87	8	87	8
अभिगच्छेत्	41	9	41	11
अभिगतानां	19	7	19	7
अभिगमनेन	272	8	274	8
अभिगमनेषु	397	14	399	14
अभिगम्य	112	1	111	21
	180	14	180	14
	307	17	309	17
अभिगृहीता:	237	8	239	8
अभिगृह्य	243	7	245	7
अभिप्रसते	222	12	224	12
अभिप्रहृचिन्ता	3	15	3	15
	276	14	278	14
अभिप्रहे	363	12	365	12

	First Edition		Second Edition	
	Page	Line	Page	Line
अभिजानाति	 34	3	34	3
अभिजुहुयात्	 419	14	421	14
	420	14	422	13
अभिज्ञात	 81	18	81	18
	209	10	211	10
अभिज्ञातान्	 111	17	111	17
	355	7	357	7
अभिज्ञानं	 395	8	397	9
अभिज्ञानमुद्रा	 110	2	110	2
अभिज्ञानमुद्राणि	 377	12	379	12
अभिज्ञानानि	 394	17	396	18
अभिज्ञानार्थं	 211	9	213	9
	390	6	392	6
अभिज्ञानेन	 181	3	181	3
अभितप्तानां	 139	1	139	1
अभितुदेयुः	 13	3	13	3
अभित्यक्त	 243	10	245	10
अभित्यक्तं	 242	17	244	17
	244	8	246	8
	387	6, 12	389	6, 12
अभित्यक्तैः	 58	7	58	7
अभित्वा	 224	2	226	2
अभिदेयुः	 202	16	204	2
अभिद्रुह्यन्ति	 33	11	33	11
	253	15	255	15
आभिधानं	 71	17, 18	71	15, 16
अभिधावनं	 199	3	199	3
आभिधेयकं	 322	20	324	20
अभिनयेत्	 383	14	384	14

	First Edition		Second Edition	
	Page	Line	Page	Line
अभिप्रस्थितः	 167	12	167	13
अभिप्रायं	 363	8	365	8
अभिप्रेतं	 27	16	27	16
	390	14	392	14
अभिप्रेतः	 317	3	319	3
अभिप्रेताः	 28	3	28	3
अभिप्रेतैः	 408	13	410	13
अभिप्लुत	 427	15	429	15
अभिभर्त्सनं	 73	2	73	2
	193	8	193	8
अभिभर्त्सयेत्	 194	6	194	6
अभिभाषितः	 269	4	271	4
अभिमन्तारं	 216	13	218	13
अभिमन्त्रय	 419	20	421	20
	420	16	422	16
अभिमन्त्रयित्वा	 418	16	420	16
अभिमन्त्रयेत्	 420	19	422	19
अभिमन्त्रितं	... 16	1	16	3
अभिमन्थनेन	 394	2	396	3
अभिमन्यते	 239	12	241	12
अभिमन्यन्ते	 311	7	313	7
अभिमन्यमानः	 11	12	11	14
अभिमन्येत	 303	16	305	16
	311	4	313	4
अभिमृष्टश्लोकः	 24	14	24	12
अभिमृष्टाः	 411	12	413	12
अभिमृष्टायाः	 152	17	152	17
अभियातं	 335	19	337	19
अभियानं	 339	18	341	18

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
अभिहन्यात	 364	18; 19	366	18, 19
	365	1, 2, 4, 7, 8	367	1, 2, 4, 7, 8
	372	9, 10	374	9, 10
	391	15	393	15
	404	15	406	15
अभिहन्युः	 207	19	209	12
	384	2	386	2
	385	3	387	3
	388	7, 10, 15, 16	390	7, 10,
	397	15	399	15 [15, 16
अभिहरणं	 400	20	402	20
अभिहरतः	 230	18	232	18
अभिहरेयुः	 394	5	396	5
	400	19	402	19
अभिहसेत्	 249	8	251	8
अभिहारयेत	 343	7	345	7
	390	3	392	3
अभिहासी	 256	1	258	3
अभिहास्येषु	 249	8	251	8
अभिहितः	 365	13	367	15
अभिहितसन्धिः	 296	5	298	5
अभिहुतः	 411	18	413	18
अभिहूलितः	 372	4	374	4
अभीक्ष्णं	 210	6	212	6
	247	7	249	7
	355	7	357	7
	352	15	354	15
	395	18	397	19
	407	4	409	4

	First Edition		Second Edition	
	Page	Line	Page	Line
अमित्रात्	 352	16	354	16
अमित्रान्	 303	10	305	10
	382	13	384	13
	384	1	386	1
	423	4	425	4
अमित्रानीकं	 390	20	392	20
अमित्रापहं	 252	4	254	4
अमित्राभ्यां	 260	4	262	2
	285	3	287	3
अमित्राभ्यागमे	... 141	9	141	9
अमित्रे	 307	21	309	21
	389	16	391	16
	392	4	394	4
अमित्रेण	 300	6, 16	302	6, 16
	352	14	354	14
	354	3	356	3
अमित्रेषु	 360	5	362	5
	424	10	426	10
अमित्रैः	 252	17	254	17
अमित्रोत्साहकं	 227	10	229	10
अमित्रोद्धारी	 300	18	302	18
अभित्रोपघातं	 284	18	286	18
मित्रे	 419	5	421	5
अमुख्याय	 354	8	356	8
अमुद्रं	 127	11	127	11
अमुद्रः	 141	1	141	1
अमुद्रस्य	 128	2	128	2
अमुद्राणां	 110	4	110	4
अमूढसंज्ञानां	 148	1	148	1

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
अर्थ	9	10	9	10
	12	16	12	16
	17	3	17	3
	18	9	18	9
	34	20	34	20
	63	16	63	16
	71	15	71	15
	133	7	133	7
	151	3	151	3
	251	14	253	14
	271	4	271	4
	291	3	293	3
	359	3	361	3
	427	1	429	1
अर्थे	14	2	14	4
	28	1	28	1
	34	3	34	3
	68	10	68	10
	69	6, 8	69	6, 8
	70	13	70	11
	74	5	74	5
	150	17	150	17
	153	12	153	12
	177	3	177	3
	198	17	198	17
	223	8	225	8
	250	16	252	16
	269	6	271	6
	280	15	282	15

	First Edition		Second Edition	
	Page	Line	Page	Line
अर्थे ...	282	15	284	15
	286	6	288	6
	289	8	291	8
	331	12	333	12
	336	6	338	6
	352	5	354	5
	357	16	359	16
	377	8	379	8
	382	4, 6	384	4, 6
	383	13	385	13
	385	7, 11, 14, 15	387	7, 11,
	395	14	397	15 [14, 15
	420	3, 4	422	3, 4
	425	5, 13	427	5, 13
	428	12	430	12
	429	7	431	7
अर्थः	16	19	16	19
	70	4	70	2
	150	7	150	7
	161	12	161	12
	209	4, 16	211	4, 16
	210	2	212	2
	311	13	313	13
	349	10, 11	351	11, 12
	356	6, 13, 14, 15	358	6, 13, 14,
	356	18, 20	358	18, 20 [15
	357	1, 2	359	1, 2
	358	5, 11	360	5, 11
	359	3, 8, 11, 15	361	3, 8, 11, 15

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
अर्धतृतीयानां	 109	14	109	14
अर्धत्रयोदश	 116	1	116	1
अर्धदण्डं	 194	7	194	7
अर्धदण्डः	 59	7	59	7
	158	8	158	8
	174	6	174	6
	182	5	182	5
	185	14	185	14
	193	14	193	14
	195	9	195	10
	197	9	197	9
	199	13	199	11
	229	4	231	4
अर्धदण्डाः	 145	15	145	15
	155	2	155	2
	156	17	156	17
	158	14	158	14
	172	14	172	14
	193	15	193	15
	195	3, 4, 7	195	4, 5, 8
	224	15	226	15
अर्धद्रोणं	... 97	1	97	1
अर्धधरणावरं	 104	8	104	8
अर्धधरणिकः	 411	11	413	11
अर्धनाकुलः	... 134	11	134	11
अर्धनीराजनं	 206	16	208	9
अर्धन्यूनः	... 108	18	108	18
अर्धपणं	 84	5	84	7
अर्धपणः	... 124	12	124	12

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
अल्पशूर्यो:	... 297	9	299	9
अल्पशेष	... 64	14	64	13
अल्पसत्त्वं	 254	15	256	15
अल्पसारं	 61	7	61	7
	297	18, 19	299	18, 19
	372	10	374	10
अल्पसारस्य	 298	2	300	2
अल्पसिद्धं	 66	17	66	18
अल्पसैन्य:	 380	9	382	9
अल्पस्वादं	 341	8	343	8
अल्पहय:	... 369	16	371	16
अल्पा	 292	1, 2	293	1, 2
अल्पां	 191	5	191	5
अल्पाः	 297	10	299	10
अल्पागम	 299	3	301	3
अल्पात्	 294	2	296	2
अल्पापराधे	 68	18	68	18
अल्पायति:	 68	12	68	12
अल्पारम्भः	 299	17	301	17
अल्पार्घे	 67	4	67	2
अल्पार्घेण	 67	4	67	2
अल्पे	 65	8	65	8
अल्पेन	 67	15	67	13
	285	14	287	14
	338	2	340	2
अल्पेषु	 297	15	299	15
अल्पोदकं	 116	14	116	14
अवकाश	 157	10	157	10
	219	3	221	3

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
अवकाशदाने	 157	13	157	13
	230	13	232	13
अवकाशयोग्निनः	 293	7	295	7
अवकाशे	 191	4	191	4
	294	3	296	3
अवकिरेयुः	 387	18	389	18
अवकृष्टं	 51	16	51	16
अवकृष्टाः	 56	3	56	3
अवक्लृतिकं	... 63	4	63	4
अवक्रोशिना	 393	21	396	1
अवक्तव्यकराः	 147	16	147	16
अवक्रय	 170	7	170	8
	201	13	201	13
अवक्रयं	 198	9	198	9
	205	10	207	2
अवक्रयणं	 167	10	167	11
अवक्रीतक	 198	13	198	13
अवक्रीतकं	 179	7	179	7
	213	20	215	20
	243	3	245	3
अवक्षिपेत्	... 16	9	16	10
	398	18	400	17
अवक्षिप्त	 248	21	250	21
अवक्षिप्तं	 17	3	17	3
	377	4	379	4
अवक्षिप्तः	 16	14	16	14
अवक्षुण्णा	 422	7	424	7
अवक्षेप	 52	6	52	8
अवक्षेपः	 93	4	93	4

	First Edition		Second Edition	
	Page	Line	Page	Line
अनयः	 162	8	162	8
अवयवान्	 358	15	360	15
अवयवानां	 322	17	324	17
अवयाने	 135	11	135	11
अवरं	 133	1, 2	133	1, 2
	85	17	85	17
	240	8	242	8
अवरः	 72	5	72	5
	133	11	133	11
	136	17	136	17
अवरयुद्धकालः	 342	4	344	4
अवरवर्णप्रायः	 256	10	258	12
अवरवर्णप्राया	 294	18	296	18
अवराणां	 96	10	96	10
अवरान्नं	 95	16	95	16
अवरार्ध्याः	 175	13	175	13
अवरुरणं	 92	18	92	19
अवरुद्धं	 16	10	16	11
	36	16	36	17
	51	3	51	3
	252	18	254	18
	336	4	338	5
	377	4	379	4
	384	10	386	10
	386	6	388	6
अवरुद्धः	 138	8	138	8
अवरुद्धदेशं	 390	21	392	21
अवरुद्धवृत्तम्	 1	12	1	12
	36	14	36	16

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
अवश्यं	 394	19	397	1
अवश्यतां	 317	19	319	19
अवश्यभर्तव्याः	 20	2	20	2
अवश्यसैन्यं	 288	7, 9	290	7, 9
अवश्येन्द्रिय	 11	10	11	10
अवसन्धेयतां	 279	3	281	3
अवसरप्रतिसन्धानेन	 214	1	216	1
अवसरे	 276	6	278	6
अवसारं	 58	9	58	9
अवसारकः	 58	11	58	11
अवसार्यते	 91	1	91	1
अवासितानि	 19	8	19	8
अवसीदति	 295	10, 18	297	10, 18
अवस्रुतः	 94	18	94	18
अवस्रुतं	 363	18	365	19
अवसृजेत्	 403	15	405	15
अवसृजेयुः	 33	11	33	11
	388	7	390	7
अवसृज्य	 391	14	393	14
अवसृतानां	 172	6	172	6
अवसृष्टं	 61	6	61	6
अवस्कन्द	 400	7	402	7
अवस्कन्दं	 377	13	379	13
	391	11	393	11
	401	11, 13	403	11, 13
अवस्कन्दः	 281	2	283	2
	372	16	374	16
अवस्कन्दक	 227	3	229	3
अवस्कन्दकाले	 387	7	389	7

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
अवाप्स्यामि	307	10	309	11
अवामान	62	14	62	14
अवारयतां	146	10	146	10
अवार्य	146	10	146	10
अवास्तव्यानां	120	4	120	4
अवास्रावयेत्	390	2	392	2
अविकारि	289	16	291	16
अविक्रम्य	166	5	166	5
अविक्रमः	113	6	113	6
अविक्रीतेन	205	4	206	14
अविक्रीतेषु	205	7	206	17
अविक्रेयं	187	17	187	18
अविक्षीरेण	416	18	418	18
अविक्षेपः	246	16	248	17
अविगृहीताः	68	6	68	6
अविच्छिन्नः	160	6	160	6
अविज्ञातं	65	3	65	3
	277	14	279	14
	353	19	355	19
अविज्ञातः	405	15	407	15
अविज्ञातस्थानगमनपण्यं	212	14	214	14
अविज्ञाते	59	7	59	7
अविज्ञातोत्पन्नं	161	14	161	14
अविज्ञाने	227	8	229	8
अविदूरस्थान्	177	8	177	8
अविद्यमानं	190	10	190	10
	213	7	215	7
अविद्याविनयः	325	7	327	7
अविद्विष्टं	290	8	292	8

	First Edition		Second Edition	
	Page	Line	Page	Line
अवेक्ष्य	 296	8	298	8
अवेलायां	 128	3	128	3
अवैरित्वं	 15	12	15	12
अव्यक्तं	 396	11	398	10
अव्यक्तकृपा	 79	9	79	9
अव्यग्रमनाः	 71	2	70	20
अव्यथाः	 72	3	72	3
अव्यवहार्यं	 189	3	189	4
अव्यवहार्यो	 175	16	175	16
अव्यवहितयोः	 292	4	294	4
अव्यवहिताः	 332	9	334	9
अव्यसनिनः	 271	8	273	8
	320	11	322	11
अव्याहतं	 168	6	168	6
अव्याहताः	... 270	13	272	13
अशंसतः	 146	14	146	14
अशक्तः	 184	18	184	18
	190	10	190	10
	194	8	194	8
	362	14	364	14
अशक्तयोः	 270	7	272	7
अशक्तिमतः	 354	7	356	6
	399	2	401	2
अशक्तया	 335	20	337	20
	336	8	338	8
अशक्यं	 329	20	331	20
	406	7	408	7
अशक्यः	 265	11	267	11
	352	4	354	4

	First Edition		Second Edition	
	Page	Line	Page	Line
अश्व	69	18	69	18
	96	17	96	17
	122	11	122	10
	130	9	130	9
	131	9	131	9
	140	8	140	8
	145	18	145	18
	172	7	172	7
	227	4	229	4
	241	6	243	6
	245	15	247	13
	247	6	249	6
	298	10	300	10
	305	12	307	12
	361	17, 20	363	17, 20
	336	19	365	20
	367	20	369	19
	369	16	371	16
	371	4, 20	373	4, 20
	374	8	376	8
	375	3	377	3
	384	18	386	17
	388	3, 7	390	3, 7
	398	13	400	12
	403	9	405	9
	409	14	411	14
अश्वं	45	2	45	2
	269	5	271	5
	370	6, 9	372	6, 10

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
अश्वानां	409	7	411	7
	424	3	426	3
अश्वानुबन्धे	366	11	368	11
अश्वायाम	132	9	132	9
अश्वायामद्विगुणविस्तारां	132	6	132	6
अश्वालङ्कारं	134	19	134	19
आश्वि	56	1	56	1
अश्वेन	364	16	366	16
अश्वैः	363	12	365	13
	396	7	398	7
	402	16	404	16
अष्टकं	84	9	84	11
	96	5	96	6
अष्टकेन	91	10	91	10
	92	2	92	2
अष्टगुणं	64	5	64	4
	83	15	83	20
	110	12, 17	110	12, 17
	125	4	125	4
	223	8	225	8
अष्टगुणः	63	18	63	18
	65	5	65	5
	110	20	110	20
	125	7	125	7
	203	16	205	8
	230	19	232	19
	240	18	242	18
अष्टगुणात्	371	7	373	7
अष्टचत्वारिंशत्पणः	202	9	202	9

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
असिद्धिः	185	21	185	21
असिद्धौ	275	16	277	16
असीमावरोधे	232	11	234	11
असुर	380	11	382	11
असुरविजयी	380	15	382	15
असुरोपभुक्तं	152	9	152	9
असूया	349	7	351	8
अस्राष्टिः	361	2	363	2
असोदर्यं	159	14	159	14
अस्तमय	116	5	116	5
अस्तमयात्	420	4	422	4
अस्तम्भं ...	15	11	15	11
अस्ति	9	6	9	6
	73	8	73	8
	149	15	149	15
	185	6	185	6
	327	5	329	5
अस्तेनपारदारं	172	1	172	1
अस्त्र ...	140	1	140	1
	312	17	314	17
	313	4, 5	315	4, 5
अस्त्रयोः	313	4	315	4
अस्थानोत्पत्तिः	251	1	253	1
अस्थि	100	13	100	13
	102	4	102	4
	117	15	117	15
	123	1	123	1
	417	12, 15	419	12, 15
	421	18	423	19

	First Edition		Second Edition	
	Page	Line	Page	Line
आचार्या:	192	14	192	14
	196	5, 7	196	5, 8
	198	2	198	3
	246	6	248	6
	261	5	263	6
	262	19	264	18
	271	7	273	7
	273	4, 16	275	4, 16
	280	4	282	4
	287	10, 15	289	10, 15
	288	3, 8, 13, 18	290	3, 8, 13, 18
	290	12	292	12
	291	15	293	15
	294	10	296	10
	296	2	298	2
	297	11, 20	299	11, 20
	298	5, 11	300	5, 11
	301	19	303	19
	308	1	310	1
	311	16	313	16
	320	2	322	2
	323	18	325	18
	324	6, 15	326	6, 15
	329	5, 10, 15, 21	331	5,10,15,21
	330	6,13,19	332	6, 13,19
	331	4,9,16	333	4, 10, 16
	332	4	334	4
	337	11, 20	339	11, 20
	338	16	340	16

	First Edition		Second Edition	
	Page	Line	Page	Line
आढकं	133	5	133	5
	136	20	136	20
	137	1	137	1
	247	4	249	4
आढकस्य	105	8	105	8
	203	9	205	1
आढ्यवणिग्वती	295	2	297	2
आढ्यविधवां	36	4	36	4
आढ्यविधवाभि:	397	11	399	11
आढ्यान्	242	4	244	4
आणिद्वारं	166	19	166	19
आणिहर्म्ये ...	53	11	53	11
आतपप्रदानं	101	10	101	10
आतपमेघानां	116	11	116	11
आतपयोगं	116	12	116	12
आतप्तं	267	5	269	5
आतरत:	198	19	198	19
आतिथ्यं	112	11	112	10
आतिथ्यमानं	107	3	107	3
आतिपातिकानां ...	187	17	187	18
आतिवाहक	99	2	99	2
	143	4	142	4
आतिवाहिकं	128	1	128	1
आतिवाहिकै:	401	3	403	3
आतिष्ठेत्	36	7	36	9
	262	4	264	4
	263	16	265	16
	264	2, 6, 8, 14	266	2, 6, 8, 14
	267	3	269	3

	First Edition		Second Edition	
	Page	Line	Page	Line
आसन्नं	427	15	429	15
	163	15	163	15
	250	5	252	5
	265	15	267	15
	266	8	268	8
आसन्नः	400	12	402	12
आसन्नकार्येषु	17	9	17	9
आसन्नचराः	217	3	219	4
आसन्नभयात्	265	19	267	19
आसन्नव्यसनः	268	2	270	2
आसन्नस्य	386	15	388	15
आसन्नां	383	3	385	3
आसन्नाः	43	19	43	19
	183	16	183	16
	320	7	322	7
	376	9	378	9
	384	18	386	18
	385	3	387	3
	387	19	389	20
आसन्नावासान्	237	11	239	11
आसन्ने	307	15	309	15
	315	1	317	1
आसन्नेभ्यः	32	9	32	9
	217	2	219	2
आसन्नैः	29	8	29	8
	38	18	38	19
आसव	120	6	120	6
आसवयोगः	120	10	120	11
आसवसम्भारः	121	3	121	3

	First Edition		Second Edition	
	Page	Line	Page	Line
आसारव्यञ्जनः	405	2, 6	407	2, 6
आसारणां	342	2	344	2
आसाराभ्यां	272	3	274	3
आसारौ	31	11	31	11
	281	12	283	12
आसीत्	27	17	27	17
आसीत	27	12	27	12
	44	16	44	15
	185	11	185	11
	261	15	263	15
	267	19	269	19
	270	11, 14	272	11, 14
	271	6, 11	273	6, 11
	337	6	339	6
	391	16	393	16
आसुरः	151	15	151	15
आसुरी	356	4	358	4
	360	19	362	19
	361	2	363	2
आसेरक	100	12	100	12
आस्कन्दं	292	15	294	15
आस्तरण	43	13	43	12
	112	20	112	19
	114	11	114	10
	138	13	138	13
आस्तरक	21	1	21	1
	44	6	44	6
	314	3	316	3
आस्तारं	132	9	132	9

इ

	First Edition		Second Edition	
	Page	Line	Page	Line
उक्तं	 322	16	324	16
	325	2	327	2
	329	5	331	5
	342	9	344	9
	344	13	346	13
	351	16	353	16
	355	5	357	5
	382	16	384	16
	398	7	400	6
	429	6	431	6
उक्तः	 31	6	31	7
	286	16	288	16
	326	8	328	8
	385	7, 11, 14	387	7, 11, 14
उक्तस्य	 75	4	75	4
उक्ता	 256	4, 11	258	6. 13
	368	18	370	18
	428	10	430	11
उक्ताः	 21	13	21	13
	299	6	301	6
	383	18	385	18
उक्ते	 149	7	149	7
उक्तेन	 426	6	428	6
उक्त्यादिषु	 397	18	399	18
उक्त्वा	 31	19	31	19
उक्षाणं	 233	6	235	6
उक्षाणः	 129	3	129	3
	172	11	172	11
उग्रः	 164	20	164	20

	First Edition		Second Edition	
	Page	Line	Page	Line
उत्पत्तिः	64	17	64	16
	313	12	315	12
उत्पद्यते	69	7	69	7
उत्पन्नः	62	3	62	3
उत्पन्नान्	336	15	338	15
उत्पन्नानां	333	4	335	4
उत्पन्नानि	275	4	277	4
उत्पन्ने	65	7	65	7
	164	16	164	16
	379	11	381	11
उत्पथिकाः	111	1	111	1
	144	16	144	16
उत्पल	76	19	76	19
	415	20	417	20
उत्पलकन्द	412	14	414	13
उत्पलगन्धि	78	18	78	18
उत्पाटयेत्	228	6	230	6
उत्पाटितं	93	2	93	2
उत्पाट्य	93	2	93	2
	291	8	293	8
	356	20	358	20
	386	12	388	12
उत्पातिक	62	17	62	17
उत्पातः	416	6	418	6
उत्पादयति	287	8	289	8
उत्पादयेत	18	6	18	6
	35	2, 4	35	2, 4
	98	8	98	8
	275	3	277	3

	First Edition		Second Edition	
	Page	Line	Page	Line
उपग्रह	269	1	271	1
उपग्रहविघाताभ्यां	330	1	332	1
उपग्रहात्	357	13	359	13
उपग्रहार्थं ..	377	8	379	8
उपग्रहे	296	4	298	4
	405	12	407	12
	36	8	36	8
उपग्रहेण	252	3	254	3
	304	3	305	3
	307	3	309	3
	376	14	378	14
उपग्रहौ	73	13	73	13
उपग्राहयेत्	127	11	127	11
	252	13, 18	254	13, 18
	310	5, 11	312	5, 11
	345	9	347	11
	406	19	408	19
उपग्राहिण:	20	17	20	17
उपग्राहै:	274	12	276	12
उपघात	5	13	5	13
	264	1	266	1
	310	15	312	15
	304	14	306	14
	67	13	67	11
उपघातं	262	9	264	8
	263	6	265	6
	284	18	286	18
	308	10	310	10
	399	3	401	3

	First Edition		Second Edition	
	Page	Line	Page	Line
उपनिधत्ते	69	10	69	10
उपनिधानं	74	10	74	10
उपनिधि	119	10	119	10
	147	17	147	17
उपनिधिं	177	17	177	17
	178	4	178	4
	191	2	191	2
	213	20	215	20
उपनिधिः	177	13	177	13
उपनिधिना	179	2, 6, 11, 14.	179	2, 6, 11,
	180	4, 6.	180	4, 6. [14.
उपनिधिभोक्ता	178	1	178	1
उपनिपात	171	11	171	11
	187	10	187	12
	188	1	188	2
उपनिपातः	187	12	187	13
उपनिपातप्रतीकारः	3	1	3	1
	208	10	210	10
उपनिपाताभ्यां	201	1	201	1
उपनिर्गच्छ	404	12	406	12
	405	3	407	3
उपनिविष्टं	333	14	335	14
	334	18	336	18
उपनिविष्टसमाप्तयोः	334	18	336	18
उपनिवेश	131	6	131	6
उपनिवेशेत	48	11	48	10
उपनिषत्	263	3	265	3
उपनिषत्प्रणिधिभिः	263	3	265	3
उपनिषत्प्रतिषेधः	238	6	240	6

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
उपलिङ्गनं	181	6	181	6
	196	10	196	10
	214	4	216	4
उपलिङ्गनात्	184	10	184	10
	231	1	233	1
उपलिङ्गनेन	214	6	216	6
उपवनवृक्षेण	242	10	244	10
उपवनान्ते	378	9	380	9
उपवसति	412	17	414	17
उपवाद:	193	8	193	8
उपवास:	366	6	368	6
उपवासव्रतैः	191	10	191	11
उपवासस्य	171	10	171	10
उपवासा:	171	19	171	18
उपवासी	420	6. 18.	422	6, 19
	421	12	423	13
उपवासेन	218	17	220	17
उपवाहनै:	330	3	332	3
उपवाहयेत्	231	11	233	11
उपवाह्यानां	136	6	136	6
	361	16	363	16
उपविचार:	137	17	137	17
	138	2, 6, 7.	138	2, 6, 7.
उपविशेत्	248	14	250	14
उपवेणुक:	134	3	134	3
उपवेधकान्	227	4	229	4
उपशयानं	236	5	238	5
	243	13	245	13
उपशालं	172	4	172	4

	First Edition		Second Edition	
	Page	Line	Page	Line
उपस्थानं	63	2	63	2
	94	10	94	10
	138	1	138	1
	361	15	363	15
उपस्थनगतः	38	17	38	18
उपस्थानानि	93	15	93	15
उपस्थापयति	149	8	149	8
उपस्थापयेत	185	12	185	12
उपस्थाप्य	391	16	393	16
उपस्थायिक	246	4	248	4
उपस्थायिनः	246	6	248	6
उपस्थास्ये	36	13	36	15
उपास्थित	313	11	315	11
उपस्थितं	37	1	37	1
	185	5	185	5
	265	13	267	12
	318	16	320	16
उपस्थितस्य	110	8	110	8
	178	10	187	17
उपस्थितानर्थे	282	7	284	7
उपस्थिते	64	8	64	7
	149	8	149	8
उपस्नेह	101	11	101	11
उपस्नेहां	58	1	58	1
उपहत	263	20	265	20
उपहतः	24	17	24	15
	333	2	335	2
उपहताः	67	12	67	10
	270	18	272	18

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
उपांशुना	310	12	312	12
उपाख्यानं	74	9	74	9
उपगतं	132	2	132	2
	304	5	306	5
उपात्त	315	7	317	7
उपादधतः	195	14	195	15
उपादान	300	3	302	3
	301	5	303	5
उपादानं	261	11	263	11
	398	12	400	11
उपाधिभ्यः	250	6	252	6
उपाय	4	14	4	14
	396	6	398	6
उपायं	351	8	353	8
	353	3	355	3
उपायः	7	5	7	3
	424	17	426	18
उपायश्चतुर्वर्गः	355	2	357	2
उपायतः	381	17	383	17
उपायन	401	12	403	12
उपायनं	65	16	65	16
उपायविकल्पजाः	361	4	363	4
उपायाः	66	14	66	15
	67	9	67	7
	74	8	74	8
	90	15	90	15
	355	6	357	6
	360	5, 13.	362	5, 13.
उपायान्	319	2	321	2

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
उपेतः	30	3	30	3
	71	1	70	19
	256	9	258	11
उपेताः	68	2	68	2
उपेयात्	31	6	31	7
	44	15	44	14
	153	18	153	18
	262	8, 13, 18.	264	7, 12, 17.
	265	2	267	2
	267	7	269	7
	277	16	279	16
	278	1, 5	280	1, 5
	304	15	306	15
	316	16	318	16
	364	10	366	10
	370	4	372	4
उपैति	57	2	57	2
उपैभि	420	10	422	10
उपोदका	414	17	416	18
उपोषितः	416	17	418	17
	417	1, 4, 10.	419	1, 4, 10.
	418	12	420	12
	419	13	421	13
	420	13	422	13
	421	3	423	3
	422	11	424	11
उपोषिष्यन् ...	339	17	341	17
उब्जयेत्	389	8	391	8
	390	2	392	2

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
उभय	289	19	291	19
	381	8	383	8
	399	2	401	2
उभयं	79	1, 7, 10, 13.	79	1, 7, 10, 13.
	91	15	91	15
	98	6	98	6
	149	13	149	13
	164	4	164	4
	169	3	169	4
	230	16	232	15
	237	16	239	16
	315	15	317	15
	328	7, 17	330	7, 17.
	346	16	348	18
	356	4	358	4
उभकक्तं	214	15	216	15
उभयत:	45	4	45	4
	53	3	53	3
	58	1, 5, 9.	58	1, 5, 9
	103	16	103	16
	214	15	216	15
	266	18	268	18
	278	20	280	20
	284	4	286	4
	289	11	291	11
	304	10	306	10
	315	3	317	3
	357	14, 19, 21.	359	14, 19, 21.
उभयत:	358	4, 8, 11.	360	4, 8, 11.

ऊ

ऋ

औ

	First Edition		Second Edition	
	Page	Line	Page	Line
कथयेन्	 269	6	271	6
कथयते्	 248	10	250	10
कथयेत्	 354	8	356	8
	394	17	396	18
	395	7	397	8
कथयेयुः	 384	19	387	1
	393	16	395	16
	395	13	397	14
	396	1	398	2
	397	1	399	1
कथा	 219	3	221	3
कथानां	 26	9	26	9
कथायां	 250	12	252	12
कथायोगेषु	 15	9	15	9
कथितं	 385	4	387	4
कदर्यः	 25	1	25	1
	69	8, 10	69	8, 10
कदर्यवर्जं	 161	15	161	15
कदर्यान्	 69	5	69	5
कदर्याभियोगिनां	 300	11	302	11
कदळी	 79	11, 13, 14	79	11, 13, 14
	82	19	83	1
कन्द	 112	14	112	13
	113	9	113	9
	115	12	115	12
	192	5	192	5
	412	14	414	13
कन्दमूल	 95	4	95	4
	100	8	100	8

	First Edition		Second Edition	
	Page	Line	Page	Line
कर्म	4	1	4	1
	14	11, 16	14	13, 18
	15	8	15	8
	18	13, 19	18	13, 19
	27	7	27	7
	32	4	32	4
	43	1	43	1
	44	6	44	6
	47	5	47	5
	63	7	63	7
	71	6	71	4
	74	11	74	11
	81	9	81	9
	83	16	83	17
	85	11	85	11
	89	15	89	15
	94	5	94	5
	102	15	102	15
	112	16	112	16
	114	5,7,14,20	114	4,6,13,19
	115	1. 18	115	1, 17
	124	2, 3	124	2, 3
	133	18	133	18
	134	1	134	1
	135	15, 16	135	15, 16
	139	1	139	1
	142	12	142	12
	150	2	150	2
	184	4, 16	184	4, 16

	First Edition		Second Edition	
	Page	Line	Page	Line
कर्म	186	17, 19	186	17, 19
	200	16	200	16
	202	10	203	14
	204	4	205	13
	206	17	208	11
	211	10, 14	213	10, 14
	217	10	219	10
	218	3	220	3
	219	2, 5, 17	221	2, 5, 18
	220	1, 2	222	1, 2
	223	15	225	15
	243	18	245	18
	244	11	246	11
	252	4	254	4
	253	20	255	19
	257	15	259	17
	258	3	260	3
	262	2	264	2
	264	1	266	1
	283	8	285	8
	285	11, 12, 13	287	11, 12, 13
	290	17	292	17
	293	11	295	11
	296	14	298	14
	297	13	299	13
	299	6, 7	301	6, 7
	320	4	322	4
	322	9	324	9
	338	8, 13	340	8, 13

	FIRST EDITION		SECOND EDITION	
	Page	Line	Page	Line
काण्डभेदना:	 102	7	102	7
काण्डनिचय	 403	4	405	4
काण्डबीजानां	 117	15	117	15
काण्डेळी	 97	11	97	11
कात्यायन:	 251	7	253	7
कान्तः	 256	7	258	7
कान्तनावर्क	 79	5, 6	79	5, 6
कान्तापरं	 212	17	214	17
कान्तार	 237	1	239	1
कान्तारं	 231	7	233	7
	363	14	365	15
कान्तारकाणां	 174	4	174	4
कान्तारे	 199	11	199	10
कानीन:	 164	10	164	9
कापटिक	 17	2	17	2
	18	7	18	7
	246	12	248	13
कापटिकः	 18	9	18	9
कापटिकमुखः	 236	11	238	11
कापटिकमुखेन	 244	14	246	14
कापाटिकाः	 242	3	244	3
कापाटिकैः	 34	9	34	9
कापिशायनं	 120	16	120	16
काम	 9	11	9	10
	11	6	11	8
	217	11	219	11
	248	13	250	13
	250	7	252	8
	256	2	258	4

	First Edition		Second Edition	
	Page	Line	Page	Line
कारयेत्	58	4,7,12,14	58	4,7,12,14
	62	11, 18	62	11, 18
	64	3	64	2
	68	3	68	3
	83	16	83	21
	83	18	84	2
	84	2, 4, 11	84	4, 6, 13
	85	12	85	12
	89	14	89	14
	98	3	98	3
	101	8	101	8
	103	2,15,17,18	103	2,15,17,18
	103	19,20,21	103	19,20,21
	104	1, 3	104	1, 3
	105	3. 14, 19	105	3. 14, 19
	112	16	112	15
	113	17	113	17
	115	7, 16	115	7, 15
	114	7, 12, 16	114	7, 11, 15
	119	3, 17	119	3, 17
	122	3	122	3
	123	9	123	9
	135	10	135	10
	137	10	137	10
	139	14, 18	139	14, 18
	141	13	141	13
	142	7	142	7
	150	2	150	2

	First Edition		Second Edition		
	Page	Line	Page	Line	
कारयेत् ...	161	12	161	13	[19
	166	4,6.12,15,19	166	4,6 12,15;	
	167	1, 3	167	1, 3	
	172	4	172	4	
	185	7	187	7	
	197	16	197	16	
	206	3	208	3	
	206	3	207	12	
	206	8,10,15,16	208	1,3,8,9	
	207	14	209	14	
	208	1	209	14	
	208	5	210	5	
			210	2	
	219	2, 5, 19	221	2, 5, 18	
	220	2	222	2	
	243	19	245	19	
	252	10,16,20	254	10,16,20	
	253	10	255	9	
	254	11,16,17	256	11,16,17	
	303	18	305	18	
	313	14	315	14	
	362	2,4,7	364	2,4,7	
	373	1	375	1	
	390	7	392	7	
	392	7	394	7	
	399	21	401	21	
	404	14	406	14	
	407	7,13,15	409	7,13,15	

	First Edition		Second Edition	
	Page	Line	Page	Line
काल	 101	8	101	8
	114	19	114	18
	177	1, 8	177	1, 8
	200	2, 16	200	2, 16
	205	9	207	1
	214	6	216	6
	255	21	258	2
	278	6, 10	280	6, 10
	290	12	292	12
	293	4	295	4
	298	18	300	18
	306	12	308	12
	307	16	309	316
	313	18	315	18
	316	8	318	8
	337	4	339	4
	372	20	374	20
काल	 66	5	66	5
	68	5	68	5
	78	8, 13	78	8, 13
	130	16	130	16
	158	17, 18	158	17, 18
	271	4	273	4
	277	9, 19	279	9, 19
	362	13	364	13
काल:	 60	21	60	21
	213	14	215	14
	253	19, 20	255	18, 19
	338	11	340	11
	339	1	341	1

	First Edition		Second Edition	
	Page	Line	Page	Line
कुट्टनशीलयोः	 167	15	167	16
कुट्टयेत्	 86	4	86	4
कुट्टाक	 115	17	115	16
कुट्टिनीं	 166	15	166	15
कुट्टिम	 58	3	58	3
कुठार	 102	7	102	7
कुठारी	 54	5	54	5
कुडुम्बं	 119	8	119	8
कुडुम्ब :	 96	13	96	13
	133	7	133	7
कुडुम्बस्य	 105	10	105	10
कुडुम्बाः	 104	20	104	20
	105	20	105	20
कुडुम्बार्थेन	 123	10	123	10
कुड्यं	 58	10	58	10
कुड्यस्य	 214	12	216	12
कुड्यच्छाया	 212	19	214	19
कुण्ठाः	... 297	12	299	12
	332	13	334	13
कुण्ठेषु	 297	14	299	14
कुण्डं	 58	15	58	15
	381	5	383	5
कुतस्त्याः	 110	2	110	2
कुतूहलाः	... 418	3	420	3
	419	7	421	7
	420	2	422	2
कुत्सनं	 193	8	193	8
कुत्सयेयुः	 242	3	244	3
कुत्सा	 251	3	253	3
	310	15	312	15

	First Edition		Second Edition	
	Page	Line	Page	Line
कुर्यात्	125	15	125	15
	126	12	126	12
	131	19	131	19
	135	3	135	3
	149	18, 21	149	18, 21
	153	3	153	3
	168	14, 19	168	14, 19
	172	15, 17	172	15, 17
	181	8	181	8
	184	2	184	2
	185	4, 10	185	4. 10
	192	19	192	19
	203	11	205	3
	205	5	206	15
	206	18	208	11
	207	3	208	14
	209	4, 9, 17	211	4, 9, 17
	210	3	212	3
	215	8	217	8
	217	15	219	15
	220	10	222	10
	222	12, 15, 20,	224	12, 16, 20
	223	3, 6	225	3, 6
	242	8, 18	244	8, 18
	246	20	248	21
	247	4, 5, 8, 10	249	4, 5, 8, 10
	248	17	250	17
	253	9	255	8
	268	14	270	14

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
कुर्यात्	269	14	271	14
	271	8	273	8
	280	12, 13	282	12, 13
	286	10	288	10
	306	15	308	15
	310	14, 15	312	14, 15
	316	9, 13	318	9, 13
	317	6	319	6
	342	12, 14	344	12, 14
	343	10, 17	345	10, 17
	352	5	354	5
	369	16	371	16
	371	4	373	4
	372	5	374	5
	381	8	383	8
	390	11, 14	392	11, 14
	397	8	399	8
कुर्युः	21	5	21	5
	22	15	22	15
	29	7	29	7
	44	6	44	6
	47	15	47	15
	48	14	48	13
	68	6	68	6
	69	17	69	17
	89	15	89	15
	116	19	116	19
	121	15	121	15
	141	9	141	9

	First Edition		Second Edition	
	Page	Line	Page	Line
कुर्युः	142	15	142	15
	144	20	144	20
	145	2	145	2
	147	12	147	12
	169	2	169	2
	171	12	171	12
	173	9, 13	173	9, 12
	176	5	176	5
	186	17	186	17
	188	15	188	17
	200	2, 5, 13, 16	200	2, 5, 13, 1
	204	15	206	7
	205	17	207	9
	207	13	209	6
	208	4	210	4
	209	11	211	11
	213	11	215	11
	220	15	222	15
	240	15	242	15
	246	16	248	17
	247	7	249	7
	304	1	306	1
	351	6	353	6
	378	4	380	4
	388	9	390	9
	396	19	398	18
	400	8	402	8
	401	2	403	2
	408	15	410	15

	First Edition		Second Edition	
	Page	Line	Page	Line
क.श	132	5	132	5
	221	9	223	9
	255	11	257	11
	259	8	261	8
	265	9	267	9
	268	7	270	7
	291	12, 14	293	12, 14
	292	6 11	294	6, 11
	294	6	296	6
	304	9, 14	306	9, 14
	309	11. 20	311	11, 20
	316	3, 21	318	3, 21
	317	12	319	12
	320	1	322	1
	321	11	323	11
	322	10	324	10
	339	5	341	5
	347	16	349	18
	361	16	363	16
	369	3	371	3
	377	1, 20	379	1, 20
	379	11	381	11
	381	3	383	3
	393	11	395	11
	407	11, 19	409	11, 19
कोशम्	65	14	65	14
	110	10	110	10
	168	7	168	7
	240	6	242	6

	First Edition		Second Edition	
	Page	Line	Page	Line
कोशम्	 241	17	243	17
	242	8	244	8
	281	17	283	17
	321	14	323	14
	346	11	348	13
	393	4	395	4
कोशः	 55	16	55	15
	85	6	85	6
	301	19	303	19
	321	15, 17	323	15, 17
	322	3, 5	324	3, 5
	358	14	360	14
	363	5	365	7
कोशे	....	....	203	4
कोशकरः	 294	6	296	6
कोशक्षयः	 65	19	65	19
कोशगृह	 40	4	40	4
कोशगृहं	 57	9	57	9
	58	6	58	6
कोशदण्ड	 321	19	322	19
कोशदण्डः	 320	17	322	17
कोशदण्डबलम्	 259	15	261	15
कोशदण्डयोः	 322	4	324	4
कोशदण्डशक्तिम्	 323	10	325	10
कोशदण्डस्य	 322	5	324	5
कोशदण्डाः	 321	7	323	7
कोशदण्डाभ्यां	 85	7	85	7
	357	3	359	3
कोशदण्डवृत्तिः	 321	4	323	4

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
कौटिल्यः	254	1	256	1
	261	9	263	9
	262	20	264	19
	271	8	273	8
	273	5, 17	275	5, 17
	280	5	282	5
	287	11, 16	289	11, 16
	288	4, 9, 14, 19	290	4,9,14,19
	290	13	292	13
	291	16	293	16
	294	11	296	11
	296	3	298	3
	297	12	299	12
	298	1, 6, 12	300	1, 6, 12
	302	1	304	1
	306	17	308	17
	308	2	310	2
	311	17	313	17
	320	9, 20	322	9, 20
	321	7, 15	323	7, 15
	322	12	324	12
	323	19	325	19
	324	7, 16	326	7, 16
	325	18	327	18
	326	11, 17	328	11, 17
	327	5, 18	327	5, 18
	328	5	330	5
	329	6, 11, 16	331	6, 11, 16
	330	1, 7, 14	332	1, 7, 14

	First Edition		Second Edition	
	Page	Line	Page	Line
क्रोता	317	13	319	13
क्रतारं	209	20	211	20
	210	6	212	6
	295	6	297	6
	381	11	383	11
क्रेतुम्	168	2, 6	168	2, 6
क्रैत	83	13	83	13
	84	10	84	12
	119	5	119	5
	183	5	183	5
	204	14	206	6
	401	4	403	4
क्रेतृसङ्घर्षे	110	10	110	10
क्रेतृणां	120	1	120	1
क्रोध	248	13	250	13
	256	2	258	4
क्रोधवशेन	217	11	219	11
क्रोधविषं	25	11	25	11
क्रोधाभ्यां ...	9	11	9	11
क्रोश	45	16	45	16
क्रोशति ...	40	17	40	17
क्रोष्टुकादीनि	100	10	100	10
क्रौञ्च	97	5	97	5
	122	12	122	11
	415	1	417	1
	416	3	418	3
क्रौञ्चः	40	18	40	18
	251	8	253	8
क्लान्त	404	5	406	5

	First Edition		Second Edition	
	Page	Line	Page	Line
क्षेत्रपथं	 171	6	171	6
क्षेत्रपथहिंसा	 173	3, 17	173	3, 16
क्षेत्रविवादं	 169	2	169	2
क्षेत्राग्रं	 142	6	142	6
क्षेत्राणां	 142	6	142	6
क्षेत्राणि	 47	1	47	1
	142	17	142	17
	247	1	249	1
क्षेत्रानुगताः	 126	14	126	14
क्षेत्राभिरत	 48	14	48	13
क्षेत्रिकस्य	 171	10	171	10
क्षेत्रिणः	 164	2	164	2
क्षेत्रे	 35	4	35	4
	118	11	118	13
	163	17	163	17
	421	15	423	16
क्षेत्रेण	 332	4	334	4
क्षेत्रेभ्यः	 113	10	113	10
क्षेपणः	 87	15, 16	87	15, 17
क्षेपाद्गुणं	 223	5	225	5
क्षेपेण	 390	13	392	13
क्षेप्तुं	 352	4	354	4
क्षेप्तुः	 150	11	150	11
क्षेप्यः	 403	9	405	10
क्षेम	 9	1	9	1
	10	3	10	3
	305	1	307	1
क्षेमं	 307	12	309	12
क्षेमाः	 291	11	213	11

ख

	First Edition		Second Edition	
	Page	Line	Page	Line
	330	15	332	15
	414	16	416	17
	415	15	417	15
	416	2	418	2
गच्छन् ...	266	2	268	2
गच्छन्त्या	158	13	158	13
गच्छामः	394	7	396	8
गच्छेः ...	173	10	176	10
गच्छेत्	10	14	10	14
	14	11	14	14
	30	8, 9	30	8, 9
	38	14	38	15
	39	1	39	1
	44	18, 20	44	17 19
	45	3, 5, 6	45	3, 5, 6
	47	17	47	17
	99	5, 11	99	5, 11
	110	10	110	10
	111	4	111	4
	114	8	114	8
	153	5, 17, 19	153	5, 17. 19
	159	12	159	12
	168	7	168	7
	176	11	176	11
	182	16	182	16
	230	4	232	4
	234	6	236	6
गच्छेत	251	15	253	15
	252	7	254	7

	First Edition		Second Edition	
	Page	Line	Page	Line
गता	 429	9	431	9
गतागतं	... 280	16	282	16
गतागतः	 279	6,9,10,11	281	6,9,10,11
गतानां	 172	16	172	16
गतिं	 69	13	69	13
गतिः	 70	10, 11	70	8, 9
	298	6	300	6
	365	15	367	17
गते	 392	4	394	4
गत्वा	 211	2	213	2
	373	3	375	3
	384	7	386	7
गदं	 244	13	246	13
गदा	 101	16	101	16
गन्तुं	 157	16	157	16
	211	3	213	3
	229	9	231	9
	276	1	278	1
गन्ध	 43	7	43	6
	55	7	55	7
	81	16	81	16
	82	5	82	5
	113	1	113	1
	114	10	114	9
	119	17	119	17
	125	13	125	13
	204	11	206	3
	212	13	214	13
	215	4	217	4

	First Edition		Second Edition	
	Page	Line	Page	Line
गृहीत्वा	189	15	189	16
	212	6	214	6
	225	5	227	5
	314	2	316	2
	377	14	379	14
	387	16	389	16
	404	11	406	11
	416	13	418	13
	420	7	422	7
	421	5	423	5
(प्र)गृहीष्यामि	211	17	213	17
	346	16	348	18
गृहे	164	9	164	8
	167	14	167	14
	181	3	181	3
	244	11	246	11
	378	9	380	9
	385	1	387	1
	421	15, 19	423	16, 20
गृहजात	183	3	183	3
गृहोचित	166	7	166	7
गृह्णतोः	299	12	301	12
	301	12	303	12
गृह्णाति	222	19	324	19
	299	12, 15, 18	301	12, 15, 18
	300	3,8, 14, 17	302	3,8, 14, 17
	312	6	314	6
गृह्णामि	419	20	421	20
गृह्णीत	423	1	Nil.	

	First Edition		Second Edition	
	Page	Line	Page	Line
गृह्णीयात्	 89	3	89	3
	111	13	111	13
	112	15	112	14
	115	13	115	13
	121	14	121	14
	122	7	122	7
	204	16	206	8
	243	3, 4	245	3, 4
	253	14	255	13
	273	8	275	8
	286	9	288	9
	315	2	317	2
	363	12	365	13
	390	11	392	11
	Nil		423	1
गृह्णीयुः	 50	11	50	11
	90	1	90	1
	128	1	128	1
	144	18	144	18
	169	3	169	3
	172	7	172	7
	176	17	176	17
	179	7	179	7
	200	15	200	15
	241	3	243	3
	247	10	249	10
गृह्यमाणः	 218	17	220	17
गृह्यमाणाः	 332	17	334	17
गृह्या	 183	11	183	11

	First Edition Page	First Edition Line	Second Edition Page	Second Edition Line
ग्राममध्ये	156	11	156	11
	199	10	199	9
ग्राममध्येषु	384	7	386	7
ग्रामयोः	163	13	168	13
	194	10	194	10
ग्राम वृद्धाः	48	1	48	1
	169	2	169	2
ग्रामवृद्धेषु	161	5	161	5
	168	4	168	4
	178	11	178	11
ग्रामशतप्रवाह	329	7	331	7
ग्रामशोभाः	173	16	173	15
ग्र मस्य	165	17	165	17
	172	2	172	2
	230	5	232	5
	419	10	421	10
	422	3	424	3
ग्रामस्वामी	232	9	234	9
ग्रामाः	126	4	126	4
	171	4	171	3
	205	17	207	9
ग्रामाग्रं	142	1, 4	142	1, 4
ग्रामाणां	48	14	48	13
	142	17	142	17
	208	18	210	18
	238	17	240	17
ग्रामात्	119	5	119	5
	172	1, 4	172	1, 4
ग्रामादिकं	406	15	408	15

	First Edition		Second Edition	
	Page	Line	Page	Line
ग्राहिणः	 82	3	82	3
	117	8	117	8
ग्राहिणे	 368	8	370	3
ग्राहितः	 348	9	350	11
ग्राहैः	 388	19	390	19
ग्राह्यः	 136	11	136	11
	137	7	137	7
	175	11	175	11
ग्राह्याणां	 274	12	276	12
ग्रीवा	 88	10	88	10
	82	11	82	11
ग्रीवाभः	 43	5	43	4
ग्रीवाभञ्जने	 196	1	196	1
ग्रीष्म	 126	17	129	17
ग्रीष्मः	 109	7	109	7
ग्रीष्माणां	 60	19	60	19
ग्रीष्मान्	 130	17	130	17
ग्रीष्मे	 109	15	109	15
	136	10	136	10
	145	1	145	1
	205	17	207	9
	240	13	242	13
	339	12	341	12
ग्रैवेयकर्म	 138	3	138	3
ग्रैवे क	 138	11	138	11
ग्रै ष्मिकं	 117	5	117	5
ग्लायंति	 40	19	41	1

च

	First Edition		Second Edition	
	Page	Line	Page	Line
चमर	 100	12	100	12
चमरी	 418	10	420	10
चमसी	 95	10	95	10
चमूखला:	 418	2	420	2
चमूमुख:	 374	3	376	3
चयं	 51	18	51	18
चय:	 365	18	367	18
चर fi	 87	11	87	11
चरण	 202	14	203	18
चरणानि	 393	7	395	7
चरत:	 126	19	126	20
चरतां	 70	11	70	9
चरति	 28	8	28	8
	275	19	277	19
	324	6, 9	326	6, 9
	325	10	327	10
	331	13	333	13
	337	15	339	15
	393	7	395	7
	409	10, 20	411	9, 20
	416	9	418	9
	417	3, 8, 11	419	3, 8, 11
चरन्तः	 50	7	50	7
	70	6	70	4
चरन्ति	 332	10	334	10
चराः	 21	19	21	19
चराणां	... 315	1	317	1
चरान्	 21	17	21	17
चरामः	 208	6	210	6

	First Edition		Second Edition	
	Page	Line	Page	Line
चूर्ण	 389	13	391	13
	409	5,6,11,12,19	411	5,6,11,12,19
	414	10	416	11
	417	15	419	15
चूर्णं	 121	7	121	7
	403	9, 11	405,	9, 11
	408	17, 18	410	17, 18
	409	1, 11, 12	411	1. 11, 12
	410	2, 18	412	2, 18
	412	13, 15	414	12, 15
	414	2, 3,	416	2, 3
	416	13	418	13
	417	2	419	2
चूर्णपूर्णा	 417	12, 15	419	12, 15
चूर्णानां	 92	16	92	16
चूर्णेन	 88	6	88	6
	395	3	397	6
चूलिकं	 86	8	86	8
चूलिकायाः	 53	8	53	8
चेतनाचेतनिकं	 146	14	146	44
चेयकर्म	 1	16	1	15
चेल	 93	5	93	5
चेष्टस्व	 277	9	279	9
चेष्टा	 196	1	196	1
	320	7	322	7
	427	5	429	5
चेष्टानाशः	 320	7	322	7
चेष्टानिरोधकाः	 301	8	303	8
चेष्टिष्यते	 277	19	279	19

	First Edition		Second Edition	
	Page	Line	Page	Line
चैत्री	339	8, 15	341	8, 15
चोच	121	2	121	2
चोदना	72	9, 20	72	9, 20
चोर	223	19	225	19
	400	11	402	11
चोरं	186	3	186	3
	218	9	220	9
	226	1	228	1
चोरः	218	9, 18	220	9, 18
	230	18	232	18
चोरक	95	3	95	3
चोरगग	305	14	307	41
चोरगण:	400	12, 15	402	12, 15
चोरगण:	291	18	293	18
चोरग्रह:	65	15	65	15
चोरग्राहिणीं	211	16	213	16
चोरप्रकृतीनां	407	12	409	12
चोरप्रसर्ग	331	14	333	41
चोरभयं	19	9	19	9
चारभाण्डस्य	218	17	220	17
चोरमार्गणं	215	7	217	7
चोरमार्गे	218	18	220	16
चोररज्जुक:	141	12	141	12
चोररज्जु:	60	6	60	6
चोरवेष	218	16	220	16
चोरव्याळभयात	141	5	141	5
चोरसम:	218	9	220	9
चोरहस्तात्	231	6	233	6
			202	9

छ

ज

	First Edition		Second Edition	
	Page	Line	Page	Line
जानीयात्	 81	8	81	8
	 90	3	90	3
	102	17	102	17
	211	20	213	19
जानीयुः	 19	18	19	17
	27	8	27	8
	247	18	249	18
ज नु	 417	15	419	15
जापकं	 78	6	78	6
जामद्ग्नय	 101	13	101	13
जामदग्नय:	 12	3	12	4
जाम्बव	 94	16	94	16
जाम्भ वाज:	 77	1	77	1
जाम्बूनदं	 85	14	85	14
जायते	 157	2	157	2
	260	17	262	15
	280	19	282	19
	367	13	369	13
	402	8	404	8
जार	 159	17	159	17
जारं	 230	18	232	18
जीरः	... 230	16	232	16
	379	2	381	2
जाल	 224	16	226	16
जालक	 76	16	76	16
जालवातायन	 214	11	216	11
जालूथ:	 41	13	41	15
जाल्म:	 209	7	211	7
ज्याः	 102	2	102	2